संवत
१८६८

मानसोपचार पूजा:

श्रीगणेशायेनमः ॥ आत्मा त्वं गिरिजा पतेः परिचराः प्राणाः सरीरं ग्रहं पूजा ते विषयोपभोगर
चना निद्रा समाधिस्थितिः संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म्म क
रोमि तत्तदखिलं शंभो तवाराधनं ॥१॥ रत्नैः कल्पीतमासनं हिमजलैः स्थानं च दिव्यांवरं ना
नारत्नविभूषितं मृगमदामोदांकितं चंदनं जातीचम्पक मालतीविकसितं पुष्पं च धू
पं तथा दीपं देव दयानिधे तव प्रभो संकल्पये पुज्यतांम् ॥२॥ सौवर्ण्ये मणिनवरत्नरतंड रचितं
पात्रे भक्तं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानसं शाकानामयुतं जलं
रुचिकरं कर्पूरखण्डोज्वलं तांबुलं मनसा मया विरचितं पूजां गृहाण प्रभो ॥३॥ छ
त्रं चामरयुग्मकं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंगकौस्तुककलागितं च नृ
त्यं तथा साष्टांगं प्रणतं स्तुतीवहुविधैः चैतत्समस्तं मया संकल्पेन समर्पितं तव विभो भ

मा॰पू॰ श्रीगणेशायनमः उषसि मागधमंगलगायनै र्झटिति जाग्रहि जाग्रहि जाग्रहि अतिकृ
१ पार्द्रकटाक्षनिरीक्षणै र्जगदिदं जगदंब सुखीकुरु १ कनकमयवितर्दिशोभमाने दिशि
दिशि पूर्णसुवर्णकुंभयुक्ते मणिमयमंडपमध्यमेहि मातर्मयि कृपयैव समर्चनं गृही
तुं २ कनककलशशोभमानशीर्षं जलधरलंबिसमुल्लसत्पताकं भगवति तव संनिवा
सहेतो र्मणिमयमंदिरमेतदर्पयामि ३ तपनीयमयी सुतूलिका कमनीया मृदुलोत्तर
छदा नवरत्नविभूषिता मया शिविकेयं जगदंबितार्पिता ४ कनकमयवितर्दिस्था
पिते न्तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे भगवति रमणीयरत्नसिंहास रामः
१

[illegible]

नेस्मिन्नुपविश पदयुग्मं हेमपीठे निधेहि ५ मणिमौक्तिकनिर्मितं महांतं कनकस्तंभचतु
ष्टयेन युक्तं कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ६ दूर्वया सरसिजा
न्वितविष्णुक्रांतया च सहितं कुसुमाढ्यं पद्मरागसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः
गंधपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रं हेमपात्रनिहितं सह रत्नैरर्घ्यमेतदुर
रीकुरु मातः ८ मलयजमृगमदसितकहणजातीफलकंकोललवंगगंधयुक्तैः अमृतैरमृतैरि
नातिशीतै र्भगवत्याचमनं निधीयतां ९ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन
यत् तदिदं भवतीकरेर्पितं मधुपर्कं जननीतिगृह्यतां १० एतच्चंपकतैलमंब विविधैः पु

मा.पू.
२

धेनुकुर्धासितं न्यस्तांस्तत्र मयस्तु वर्णोच्चयैकेम्ते कुंभमद्रिहितं ११ स्नानं हंसुरसुंदरीभि
रमितो हस्तैर्धृतं तन्मया केशा भुञ्जमर्भ्रः अधिप्रसफले व्यंगकुचालिप्यतां १२ मातःकुंकु
मपंकनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरं केशा
नामलकैर्विशोध्यविशदाकस्तूरिकाधान्विते स्नानंते नवरत्नकुंभसहितैः संवा
सितोष्णोदकैः १२ दधिदुग्धघृतैः समाक्षिकैः सितयाशर्करया समन्वितैः स्नपयामि सदाह
मादृतो जननीं त्वां पुनरुष्णवारिभि १३ एलोशीरसुवासितैः सकुसुमैर्गंगादितीर्थोदकैः
माणिक्यामलमौक्तिकामृतयुतैः स्वच्छैः स्वर्णोदकैः १४ मंत्रान्वैदिकतांत्रिकान्परिप

रामः
२

ठन्सानंदमत्या हृदा स्नानं ते परिकल्पयामि गिरिजे स्नेहात्त्वमंगीकुरु १५ बालार्कद्युति
दाडिमीयकुसुमप्रस्पर्द्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मयाकल्पितं १६ मुक्ता
भिर्ग्रथितं चकंचुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्ण मंगीकुरु १७
नवरत्नमयं मयार्पितं कमनीयं तपनीयपादुके सविलासमिदं पदद्वयं कृपया देवि तयोर्नि
धीयतां १८ बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कंकतैर्मार्जयित्वा सुरभिर
रविंदैश्चंपकैर्वेष्टयित्वा झटिति कनकसूत्रैर्जूटमन्वेष्टयामि २० सौवीरांजनमेव च सुषा
वन्नविन्यस्तकनकशलाकया मयापितं तन्नयने मलिनमपि त्वद्दसिसंगाद्दुल्लंडावमिलश्व

मा०स०
२

नीमतामबाम २१ मंजीरैपदयोर्निधाय रुचिरे विन्यस्तकांचीकटौ मुक्ताहारस्तुराजमोरनु
पमानसत्रमालागले २२ केयूराणिभुजेषु रत्नवलयश्रेणीकरेषु क्रमात्ताटंके तव कर्णयोर्वि
निदधे शीर्षे च चूडामणिम् २३ धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिवि
राजिहेमतिलकं नासापुटे मौक्तिकं मातर्मौक्तिजालिकां च कुचयोः सर्वांगुलीषूर्मिकाः कट्यां
कांचनकिंकिणीर्विनिदधे रत्नावतंसं श्रुतौ २५ मातर्भालतले लतबातिविमले काश्मीरकस्तूरिका
कर्पूरागरुभिः करोमि तिलकं देहंगरागं तव २६ वक्षोजादिषु यक्षकर्दमरसं सिक्ताचंपचवद्धृतिं
पौष्टां कुंकुमलेपनादि सहितं संपूजयामि क्रमात् २७ रत्नासने त्वां परिपूजयामि मुक्ताफलै

राम:
२

र्वा स्फटिकैरविडैः अश्वत्थैर्दलिय बाहिद्रुवाकाश्मीरपंकांकिततंदुलैर्वा २८ जननि चंप
कतैलमिदं पुरोमृगमयंगमयं पटवासकं सुरभिगंधमयं च वरं तनुः समं सपरिमलं मिदं प्रति
गृह्यतां २९ सीमंतिने भगवति मया सादरं न्यस्तमेतत्सिंदूरं ते हृदयकमले हर्षवर्षं तनोतु
बालादित्यद्युतिरिव सदालोहिता यस्य कांतिरंतर्ध्वांतं हरतु सकलं चेतसा चिंतयेयम् ३०
मंदारकुंदकरवीरलवंगपुष्पैस्त्वां देवि संततमहं परिपूजयामि जातीजपावकुलचंपककेत
तकादिनानाविधानिकुसुमानि समर्पितानि ३१ मालतीवकुलहेमपुष्पिकाकांचनारकर
वीरकैतकैः कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदंब ते वपुः ३२ पारिजातशतपत्रपा
टलामल्लिकावकुलचंपकादिभिः अंबुजैश्च कुसुमैश्च सादरं पूजयामि जगदंब ते वपुः ३३

मा॰प॰पू॰ ५ लासंमिलितैस्सितांशुसहितैः श्रीवाससंमिश्रितैः कर्पूराकुलितैः सितामधुयुतैर्गोसर्पिकालो
ढितैः श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्व
मङ्गीकुरु ३४ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिकादीपितैर्दीपैर्दीर्घतरान्धकारभिदुरैर्बाला
र्ककोटिप्रभैः आताम्रज्वलदुज्ज्वलज्ज्वलनवद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नी
राजयामि सुचैः ३५ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकैः सूपापूपसिताघृ
तैः सवटकैः सक्षौद्ररंभाफलैः एलाजीरकहिंगुनागरनिशाकल्मच्चरीसत्कृतैः शाकैश्शाक
महं सुधाधिकरसैः संतर्पयामि क्रमात् ३६ साऽपूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपर
मान्नःपुरःसराणि शाकोल्लसन्मरिचजीरकबाह्लिकानि भक्ष्याणि भक्ष्य जगदम्ब मयार्पितानि ३८ रामः ५

क्षीरैमेतदमृतोपमं प्राज्यमिदमुज्ज्वलं मधु मातरेतदमृतोपमं त्वयासैन्धवेण परिपीय
तां मुदा ३९ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे कर्पूरमिश्रागरुकुंकुमेन
हस्तौ समुद्वर्त्तनसंदनेन ४० अतिशीतमुशीरवासितं तपनीयावपने निवेदितं पटपूतमिदं जि
ताऽमृतं शुचि गंगाजलमेव पीयतां ४१ आम्राश्च रंभाफलसंयुतानि द्राक्षाफलक्षोटसमन्वितानि स
बीजपूराणि सनारंगानि फलानि ते देवि समर्पयामि ४२ कलिंदकोशातकसंयुतानि जंबीर
नारंगसमन्वितानि सनारिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ४३ कर्पूरेणा
युतैर्लवंगसहितैः कंकोलचूर्णान्वितैः सुस्वादुःक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः
मातः केतकपत्रपांडुरुचिभिस्ताम्बूलवल्लीदलैः सानंदं मुखमंडनार्थमतुलं ताम्बूलमंगीकु

मा॰ पू॰ ५ रु एलालवंगादिसमन्वितानि कंकोलकर्पूरविमिश्रितानि तांबूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि ४६ तांबूलवल्लिदलनिर्जितहेमवर्णा स्वर्णाक्तपूगफलमौक्ति
कचूर्णयुक्तं रत्नस्थलीस्थितमिदं सहितैलसार्द्धं तांबूलमेतदवनाम्बुरुहे गृहाण ४७ मह
ति कनकपात्रे स्थापयित्वा विशालान् मिहिरसदृशदीपान्यकोगोधूमदीपान् वे
रुद्धताम थ ते जन्यस्तत्पातुकंपो भुवनजननि कुर्वे निर्मलारात्रिकं ते ४८ सविन
यमथ दत्वा जानुयुग्मं धरित्र्यां सपदि शिरसि धृत्वा पात्रमारात्रिकस्य मुखकमलस
मीपे ते न्यसार्द्धं त्रिवारं भ्रमयति हृदयान्ते रुपाङ्कटाक्ष ४९ अथ वरमणिभिर्मो रामः ५
यति

क्तिकैस्त्वावकीर्य्य त्रिभुवनकमनीये पूजयित्वाथ वस्त्रैः मिलितविविधमुक्तां दि
व्यलावण्यमुक्तां जननि कनकवृष्टिं दक्षिणां तेर्पयामि ५० मातः कांचनदण्डमं
डितमिदं पूर्णेन्दुबिंबप्रभं नानारत्नविशोभिहेममलं लोकत्रयाह्लादकं भास्वन्मौ
क४ क्तिकजालसंपरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं
निर्मितं ५१ सरदिंदुमरीचिगौरवर्णैर्मणिमुक्ताविलसत्सुवर्णदण्डैः जगदम्ब वि
चित्रचामरैस्त्वामहमानन्दभरेण वीजयामि ५२ मार्तण्डमण्डलनिभो जगदम्ब यो यं भ
क्त्या मया मणिमयो मुकुरोर्पितस्ते पूर्णेन्दुबिंबरुचिरं वदनं स्वकीयमस्मिन्विलो

मा॰सा॰ह॰ ६

कयस्व िलोल विलोचने त्वं ५८ इंद्राद्यानतिनतिमुकुटकोटिदीपैर्नीराजयंति सततं
तव पादपीठं तस्मादहं तव समस्तशरीरमेतन्नीराजयामि जगदंब सहस्रदीपैः प्रख्या
तिरतितुंगोरत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगंभीरघोषः भगवति क
लितायं वाहनार्थं मयाते तुरगशतसमेतो वायुवेगस्तुरंग ५९ मधुकरवृतकुंभन्य
स्तसिंदूररेणुः कनककलितघंटाकिंकिणीशोभिकंठः श्रवणयुगलचंचच्चामरोमेघ
तुल्यो जननितव मुदेस्यान्मत्तमातंगएषः श्रततरतुरंगैर्भ्राजमानं मणिमयस्तंभ
चतुष्टयेनयुक्तं कनकमयमिमं वितानवंतं भगवति तेव रथं समर्पयामि ६० ह

रामः ६

यगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तं अतिबहुचतुरंगसैन्य
मेतद्भगवति भक्तिभरेणते र्पयामि ६१ परिखीकृतसप्तसागरं बहुसंपत्सहितं
मयार्पितेद्य विपुलं धरणीतलाभिधानं प्रबलं दुर्गमहं समर्पयामि ६२ शतपत्रयुतैः
स्वभाववशितैरतिसौरभ्ययुतैः परागपीतैः भ्रमरैर्मुखरीकृतैरनंतैर्व्यजनैस्त्वां जगदं
बविजयामि ६३ भ्रमविलुलितलोलकुंतलाली विगलितमाल्यविकीर्णरंगभूमि
रियमतिरुचिरानटीनटंती तवहृदयं मुदमातनोतु मातः धृतमुरववलनविला
सलोलवेणी विलसिन्निर्जितलोलभृंगमाला युवजनसुखकारिबाहुलीलाभग

मा॰सो॰पू॰
७

वसिति ते चुरनोन नलंति वाला ६४ कचित्कुचलदीनां ना प्रक्षालेन दीनां प्रति गृह्णमथत त्र प्र
त्नहं प्रादुरासीत् धिमिकिटि ति धिमि डिंडिधी धिं धी धिधिमि धिमित तस्थे थिथेयी ति राधा ६६
श्रमद लिकुलकुल्यालोलतधम्मिल्लभाराः स्मितमुखचपलोयदृष्टिश्चलावल्पचुरा श्रन्तुप
मतवचे बावारेया षानठंति परन्तु तकलकुंडी देवि मोदं तनोतु डमरु डिंडिम ढुं ढुं ढंठ हरीन्द
दुरवडघडडघटाद्यः ऊधितिकुंकुतिमिजेग दंचिकेवु कुरवाहर्द वेसुरवयं ततेते ६९ विपं
ची क्षु मग्रस्तुरान्वाद्यं तस्मैव धारिगायं तिगंधर्व कन्या हारांसावधानेन चित्तेन मातः
समाकर्णयत्वं मया आर्थितासि ७० अमिलत कमनीये नर्त्तने नर्त्तकीनां हरणमथरम रामः
७

यित्वा चेतसां वंतवदीयं स्वयमहमपि वितेन्नृत्यवा सिग्गीते भगवति भवदीयं मानसं रंजया
मि तवेह विगुणानुकीर्त्तने चतुराननो चतुराननाद्यः नहि हेकमुखेषु जंतुषु स्तवनं कस्तवक
र्त्तुमीश्वरः नेदृषेद्या पारिपूजकेभ्यः सद्योश्वमेधादि फलं ददाति तां सर्वपापक्षयकार्यहेतुभू
तां प्रदक्षिणां ते पतितः करोमि रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखा कुलिशांकिताभ्यां अ
शेषवृन्दारकवंदिताभ्यां नमो भवानी पदपंकजाभ्यां वरणानलिनयुग्मं पंकजैः पूजयित्वा कन
ककमलमालां कंठदेशेपयित्वा शिरसि विनिहितो यं रत्नपुष्पांजलि स्ते हृदयकमलमध्ये दे
वि मोदं तनोतु ७५ अथ वातरु शारवासितं निजतांम्बूलं क्षन रंजिति तपनीयमये हि पट्टकेमु

मान॰
८

खगंदूधुजलं निधीयतां मणिमयजगं हवमेवकेस्मिन्मृदुलतितूलिकया विराजमाने अ
तिरहसि मुदा शिवेन सार्द्धं सुखशयने कुरु मात्मम्बरति ७७ मुक्ताकुंदेंदुगौरां मणिमयमुकु
टां रत्नताटंकयुक्तां अक्षस्रक्पुष्पहस्तामभयवरकरां चंद्रचूडां त्रिनेत्रां नानालंकारयुक्तां
सुरमुकुटमणिद्योतितस्वर्णपीठां सानंदां सुप्रसन्नां त्रिभुवनजननीं चेतसाचिंतयामि ७८
एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेपराधान्क्षमस्व न्यूनं
यत्तत्तव करुणया पूर्णतामेतु सद्यः सानंदं मे हृदयकमले तेस्तु नित्यं निवासः ७९ पूजा
मिमां पठेत्प्रातः पूजाकर्तुमनीश्वरः पूजाफलमवाप्नोति वांछितार्थं च विंदति ८० प्र

रामः
८

मानसोप
चारपूजाः
९

त्यहं भक्तिसंयुक्तो यो वै पूजामिमां पठेत् वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत्
८१ इति श्रीपरमहंसपरिव्राजकाचार्यपूजा संपूर्णम् शुभं भूयात् संवत १८६८ आषाढ १ गते

रामः
९